DPN 5496

Title: शरभ कवच ŚARABHA KAVACA

Run. No. 6187 Cat. No. 72 Micro. No.

Subject स्तोत्र Hymn Religion: Hindu / Bauddha

Language: Skt. / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 16 X 6·5 Folios 1–9 Lines (in a page) 7 [illegible] Ending folia missing

Compl. / Incompl. Chapt. / act / verses extant 1–98

Author / translator Scribe / donor

Date: NS / SS / VS / KS Ruler / place

Script: New. / Dev. / Bhuj. / Ran. / Illus.:

Material: palmleaf / paper / thyasaphu /

Condition: fine / damaged by worms, rats, water /

Beginning, colophon, post-colophon:

श्री गणेशाय नमः ॥ ॥ईश्वर उवाच ॥ वक्ष्यामि शृणु देवेशि सर्व रक्षणमद्भुतं ॥ शारभं कवचं नाम्ना चतुर्वर्ग फल प्रदं ॥१॥ शारभं पक्षिराजस्य कवचस्य सदाशिवः॥

૮૨
શારંગળવચ

शा॰क॰ श्रीगणेशायनमः॥ ॥ईश्वरउवाच॥ ॥वक्ष्यामिशृणुदेवेशिसर्वरक्षाणम
॥१॥ द्भुतं॥शारभंकवचंनाम्नाचतुर्वर्गफलप्रदं॥१॥ शारभंपक्षिराजाख्यंकवच
स्यसदाशिवः॥छंदोस्यबृहतीप्रोक्ताप्रोच्यतेशारभेश्वरः॥२॥देवताप्रणवोबी
जंप्रकृतिःशक्तिरुच्यते॥कीलकंपक्षिराजस्तुसर्वरक्षाकरोविभुः॥३॥परप्र
योगशांत्यर्थंसर्वशत्रुनिवृत्तये॥चतुर्वर्गार्थसिद्ध्यर्थेविनियोगस्यभावना
॥४॥ध्यानं॥रक्ताभंसुप्रसन्नंत्रिनयनममृतोन्मत्तभाषाभिरामंकारुण्यां
भोधिमीशंवरदमभयदंचंद्ररेखावतंसं॥शंखाध्मानाखिलाशाप्रतिहतवि ॥१॥

धिनाभासमानात्मभासंसर्वैशंसालुवेशंप्रणतभयहरंपक्षिराजंनमामि
॥५॥श्रीशिवःपुरतःपातुमायाधीशस्तुपृष्ठतः॥पिनाकीदक्षिणेपातुवाम
पार्श्वेमहेश्वरः॥६॥शिखाग्रंपातुमेशंभुर्ललाटंपातुशंकरः॥ईश्वरोवद
नंपातुभ्रुवोर्मध्येपुरांतकः॥७॥भ्रुवौपातुममस्थाणुःकपर्दीपातुलोच
ने॥शिवोमेश्रोत्रयोःपातुवागीशःपातुलंबिकां॥८॥नासयोर्मेवृषारूढः
नासाग्रेवृषभध्वजः॥स्मरारिःपातुमेतालरोष्ठयोर्भक्तवत्सलः॥९॥पातु
मृत्युंजयोदंतांश्चिबुकंपातुभक्तराट्॥परमेशःकपोलौमेत्रिकंपातुकपा

शि·क· लभ्रत्त॥१०॥ कंठंपशुपतिःपातुश्शूलीपातुहनुर्मम॥स्कंधद्वयंहरःपातुधूर्जटिःपा
॥२॥ तुमेभुजौ॥११॥भुजद्वयंमहादेवईशानंममकूर्परे॥मुष्टिसंधिंजगन्नाथःप्र
कोष्ठेचंद्रशेखरः॥१२॥मणिबंधेत्रिनेत्रोमेभीमःपातुकरस्तलं॥करपृष्ठंमृ
डःपातुरुद्रोंगुष्ठद्वयंमम॥१३॥उमासहायस्तर्ज्जन्योर्भर्गोमेपातुमध्यमे॥
अनामिकांकरालास्यःकालकंठःकनिष्ठयोः॥१४॥गंगाधरोंगुलीःपर्वान्य
प्रमेयोनखानिमे॥वक्षस्तत्पुरुषःपातुकुक्षौदक्षाध्वरान्तकः॥१५॥अघोरोहृ ॥२॥
दयंपातुवामदेवस्तनद्वयं॥नीलरुद्रःजठरंपातुनाभिंनारायणोस्तुतः॥१६॥

गुह्यंप्रजाकरःपातुकुक्षिपार्श्वेमहाबलः॥सद्योजातःकटिंपातुपृष्ठभागंतुभैरवः
॥१७॥मोहनोजघनंपातुगुदंममजितेंद्रियः॥उर्द्धरेतालिंगदेशंवृषणौवृषभ
ध्वजः॥१८॥ऊरुयुग्मंभवःपातुजानुयुग्मंभवान्तकः॥हुंकारंपातुमेजंघेफट्
कारोममगुल्फके॥१९॥फट्कारःपादपृष्ठंमेवषट्कारोंघ्रिकस्थले॥स्वाहा
कारोंगुलीपार्श्वेस्वधाकारोंगुलीमम॥२०॥त्वरितःसर्वसंधिंमेरोमकूपान्नृसिं
हजित्॥त्वचंपातुमनोवेगःकालजिद्रुधिरंमम॥२१॥पुष्टिदःपातुमेमांसंमे
दोमेहस्तिदोषहृत्॥सर्वात्मास्थिचमांपातुमज्जानंमजगत्प्रभुः॥२२॥भक्त

शा॰क॰ ॥३॥ वृद्धिकरःपातुबुद्धिंवाचामधीश्वरः॥मूलाधारांबुजंपातुभगवान्शरभेश्व
रः॥२३॥स्वाधिष्ठानमजःपातुमणिपूरंहरिप्रियः॥अनाहतंशालुवेशोवि
शुद्धंजीवनायकः॥२४॥सर्वज्ञानप्रदोदेवोललाटंमेसदाशिवः॥ब्रह्मरंध्रंम
हादेवः॥पक्षिराजोखिलात्मवान्॥२५॥सर्वलोकवशीकारःपातुमांपरव
र्गजित्॥वज्रमुष्टिवराभीतिहस्तःकालाग्निसन्निभः॥२६॥विजयासहि
तःपातुचैंद्रिकाकृतमग्निजित्॥शक्तिशूलकपालासिहस्तःसौदामिनीप्रि ॥३॥
यः॥२७॥जयायुतोमहाभीमःपातुवैश्वानरीदिशं॥दंष्ट्रासिमुद्गरालंशूल

पाशांकुशाकरांबुजः॥२८॥यमान्तकोजितायुक्तोदिशंपातुचदक्षिणां॥खड्गखे
टाग्निपरशुहस्तःशत्रुविमर्दनः॥२९॥अपराजितयायुक्तःसदाव्यान्नैऋ
तींदिशं॥पाशांकुशधनुर्बाणपाणिःश्रेणीयुवाग्रगः॥३०॥हरिद्राभोनिशं
पायात्वारुणींदिशमात्मजित्॥ध्वजाग्यकवचोदारःभुजोदुर्गायुतःखगः
॥३१॥चंडवेगःशिवःपायात्सततंमारुतीदिशं॥गदाक्षस्रग्वराभीतिकरां
भोजःशिवायुतः॥३२॥शरभेश्वरायनमः॥कनकांभोमहातेजःपातुकौ
वेरिकींदिशं॥त्रिशूलाहिकरालाग्निदोस्थलोविद्ययायुतः॥३३॥भस्मो

शा॰ क॰ ॥४॥ द्धूलितसर्वांगोमेश्रीपात्वपराजितः॥जपाक्षपुस्तकांभोजकमंडलुकरांबु
जः॥३४॥ऊर्ध्वंपातुगिरायुक्तःसर्वभूतहितेरतः॥शंखचक्रगदाभीतिरु
हस्तःपद्मायुतोव्ययः॥३५॥नीलांजनसमोनीलपातालंपात्वरारतं॥अनु
क्तविदिशःपातुशालवोनरसिंहजित्॥३६॥शरभःपातुसंग्रामेयुद्धेवैरि
कुलान्तकः॥सर्वसौभाग्यदःपातुजाग्रत्स्वप्नसुषुप्तिषु॥३७॥सर्वसंपत्प्रदः
पातुधनधान्यादिकंमम॥संतानदःसुतान्पातुपुत्रान्नायुःकरोनिशं॥३८ ॥४॥
बंधून्वृद्धिकरःपातुगृहंममवशंकरः॥ग्रामंग्रामेश्वरःपातुराज्यंममदि

गंबरः॥३९॥राष्ट्रंशांतिकरःपातुराज्ञानंधर्मदायकः॥मार्गंदक्षहरःपातुममक
र्मणिभैरवः॥४०॥बटुकःपातुमेसर्वमवस्थात्रितयेषुच॥स्पृत्रान्यत्रयनज
पंक्त्वाप्रतिष्ठानंसमाहितः॥४१॥प्रार्थयेदखिलंसर्वेष्टंहृदिस्थंशालवेश्वरं
॥येग्रामघातकाःक्रूराःकपाटादोष्णिकाभयाः॥४२॥तस्कराश्चात्रवंचकृद्राव
धराक्कापलासिनः॥छद्मचाराविटाग्रस्थाद्दिवाचारानिशाचराः॥४३॥तेस
र्वेपक्षिराजस्यपक्षवातपराहताः॥स्त्रीबालसहिताक्षिप्रंपितृमातृकुला
न्विताः॥४४॥गतचिन्तागतस्थानाजातुर्दृष्टांतरस्वयं॥पंचदुष्टग्रहारक्षा

शा·क· पिशाचादिवयोनयः॥४५॥चतुःषष्टिगणाःसप्तसप्तप्युन्मादकारिणः॥अष्टात्री
॥५॥ तिमहाभूतासप्तकोटिमहाग्रहाः॥४६॥प्रेतारूढाश्चयस्त्रिंशत्पिंडदानपरा
यणाः॥अयुतंक्षुद्रभेदाश्चचत्वारिंशानिवाहुया॥४७॥नातिज्वरभेदा
श्चशतभेदाश्चकृत्तिका॥पंचाशद्गुणोपाश्चनियुतंकृत्तिमग्रहा॥४८॥
द्वात्रिंशद्धक्रिवक्राश्चविंशन्मार्जारवंचकाः॥चतुःशतास्वरूपाश्चयेचान्ये
क्षुद्रयोनयः॥४९॥तेसर्वेशालुवित्रास्यत्रासंखनिश्चनमोहिताः॥विषसाख
लिनस्वांताप्राणत्राणपरायणाः॥५०॥गर्भंतुसप्रयोक्तारोदेशांतरमानि ॥५॥

रूपा॥येचान्येवनजाग्राम्याःशुनकोरगवृश्चिकाः॥५१॥सर्पाविषाःशिवाव्यालाव्या
घ्रऋक्षेभशूकराः॥गृध्राश्येनाखगाःकाकाःदंशकामत्कुणामृगाः॥५२॥एतेशरभ
रवै हस्ताग्रेनवक्षतविमोक्षकाः॥अवद्धक्षुद्रासिक्ताशीलातलनिताडिताः॥५३॥
संभेदनेनखाद्धीघ्रंनश्यंत्यखिलदुश्चराः॥नदंशंत्युरगाःक्वापिनातिवानोपिवी
जितं॥५४॥नदहत्यसहोवह्निःशायंत्वापोनचाधिकं॥नवर्षत्वतिवृष्टिश्चनपपत्य
॥६॥ शनिःक्वचित्॥५५॥नाल्पमृत्युपमृत्युश्चनरोगानाशुभंक्वचित्॥अवश्यस
३१·५१ होवांकपंजंतवोममदेशके॥५६॥नस्याद्वैरंतुजंतूनांअन्योन्येराजकेमम॥भवं

श॰क॰
॥ ६ ॥

तिसुखिनः सर्वे सर्वा सन्तु पतिव्रताः ॥ ५७ ॥ सर्वाश्चयंतु सत्पुत्रान्पौत्रांश्च शुभल
क्षणान् ॥ सर्वे सर्वाश्च नंदंतु संतु कल्याणकारकान् ॥ ५८ ॥ राजन्वती मही चा
स्तु राजा भवतु धार्मिकः ॥ संस्रवंतु पयो गावः फलं चौषधयोधिकं ॥ ५९ ॥
भवंतु फलदा दीक्षा सम्यक् भवतु मेखिलं ॥ ममास्तु तरसा नूनं श्राम्भर्यमचं नम
चलं ॥ ६० ॥ कामक्रोधमहालोभसंमोहमदमत्सराः ॥ मास्तु मेक्कापि सर्वे च भग
वन्करुणानिधे ॥ ६१ ॥ शरभेश्वर विश्वेश पक्षिराज दयानिधे ॥ देहि मे नि
श्चलां भक्तिं प्रणतोस्मि पुनः पुनः ॥ ६२ ॥ गौरीवल्लभ कामारे कालकूटवि ॥ ६ ॥

षादने ॥ मामुद्धर भवांभोधे त्रिपुरान्तककारकः ॥ ६३ ॥ शालुवेन्द्र जगन्नाथ सर्व
भूतहितेरतः ॥ पाहि मां तरसा चोरान्दुष्टान्घातय घातय ॥ ६४ ॥ कालभैरव वि
श्वेश्या विश्वरक्षपरायण ॥ रक्षस्तूषकचोरेभ्यो धान्यराशिमिमां विभो ॥ ६५ ॥
पक्षिराज महादेव प्रणतार्त्तिविनाशन ॥ तस्करेणाहृतं वस्तु द्रुतं दापय दापय ॥
॥ ६६ ॥ येमर्मवादिनः क्षुद्राः क्षुद्रोपद्रवकारकाः ॥ सर्वाचारपरित्यक्ता मानहीना
श्चरोद्धका ॥ ६७ ॥ ते सर्वे शालुवेशस्य मरालायुधचूर्णिताः ॥ नश्यंतु निमिषा
र्द्धेन पावकाग्नतूलवत् ॥ ६८ ॥ येन नाद्रोहिनोल्पाशानत्का लोच्चिभाष

शा·क·

॥ ७ ॥ ना॥ सत्कर्मविघ्नकर्त्तारः शांतभक्तेपरायणाः॥ ६९॥ तेशालुवेत्राहस्ताग्रखड्ग
निर्भिन्नदेहकाः॥ पतंतुभूतलेयाम्यांप्राणास्तेषांप्रयांत्वरं॥ ७०॥ त्वदाचारपरंभ
क्तंसाधकंमांविवेकिनं॥ येनाक्रमंतिसंग्रामेतेगच्छंतुपराहता॥ ७१॥ त्वदीये
नैवमार्गेनसंचयंतंययातुरं॥ येवदंतिपरीवादंत्रांतात्रीघ्रंभवंतुते॥ ७२॥ त्वद्धारा
ममलंघीरंयोमांतर्जयतुंबलात्॥ मनसाप्यनुमन्यंतेस्वांतंभ्रमतुतत्क्षणात्॥ ७३॥
मनसाकर्मणावाचायेद्वेक्षंत्यतिदुःसहं॥ तेमहाशोकरोगाब्धौपतंत्याशुशिवाज्ञया॥ ॥ ७ ॥
॥ ७४॥ मदीयानिपदार्थानिस्पृहीतुंयोवलोकते॥ तत्क्षणादेवनस्याक्षोभवंतात्रीघ्र

रोत्तया॥ ७५॥ मदीयंद्रव्यमादाययेगच्छंतीहतस्कराः॥ सिंहाभरिपाशसंबद्धागच्छंतुप्र
दक्षिणं॥ ७६॥ सीमाप्यंताश्चयेचौरागृहीतंद्रव्यसंचया॥ प्रवसावयवास्तेचत्राग
च्छंतुशिवाज्ञया॥ ७७॥ तस्करानित्तमास्वांतंधान्यवस्त्रधनादिकाः॥ पक्षिराजपराक्र
मासमागच्छंतुतेद्रुतं॥ ७८॥ समाहृत्वापदार्थोघादेशान्नीताश्चतस्कराः॥ शार
भेशाहलाकष्टातेगच्छंतुवशानुगाः॥ ७९॥ चौरागृहीतमद्वस्तासमागच्छंतुम
द्गृहे॥ तेशालुवेलपक्षोथवातेर्गच्छंतुसत्वरं॥ ८०॥ यांतंविवेकिनंभक्तंत्वदंघ्रि
ध्यानतत्परं॥ ब्रुवंतियेसहप्राणास्तेषांयांतुममापुरं॥ ८१॥ षड्विंशकोष्ठकेयं

त्रा·क· त्रैरेखाभूपुरमध्यगे ॥ स्वेच्छामंत्रंलिखित्वातुजपेदाराध्यसाधकः ॥ ८२ ॥ उदङ्मुखः
॥ ८ ॥ सहस्रंतुरक्षणायजपेन्निशि ॥ नष्टाहरणकेपंचरात्रयश्च उदङ्मुखः ॥ ८३ ॥ मा
रणेसप्तरात्रंतुदक्षिणाभिमुखोजपेत् ॥ रोगानिग्रहणेचाष्टरात्रमाग्नेयदिङ्मुखः
॥ ८४ ॥ इतिगुह्यंमहामंत्रंपरमंसिद्धिदायकं ॥ शारभेशाख्यकवचंचतुर्वर्गफल
प्रदम् ॥ ८५ ॥ प्रत्यहंप्रतिपक्षंवाप्रतिमासमथापिवा ॥ योजपेत्प्रतिवर्षंवाव
रेण्यःसशिवोभवेत् ॥ ८६ ॥ एवंहिजपतःपुंसःपातकंचोपपातकं ॥ सर्वंविलय
माप्नोतितिमिरंरविनायथा ॥ ८७ ॥ दशाष्टंयोजपेन्नित्यंप्रातरुत्थायसाधक ॥ सर्वं ॥ ८ ॥

सिद्धिंसमाश्रित्यदेहांतेसशिवोभवेत् ॥ ८८ ॥ त्रिकालंध्यानपूर्वंतुजपेद्द्वादशवा
र्षिकं ॥ कायेनान्येनवैदेवाजीवन्मुक्तोभवेन्नरः ॥ ८९ ॥ शतवारंजपेन्नित्यं
मंडलंयोवरानने ॥ सोणिमादिगुणान्प्राप्यविचरेत्स्वेच्छयासदा ॥ ९० ॥ आताला
दिधरण्यादिभुवनानिचतुर्दश ॥ विचरेत्कामवत्सर्वैःपूज्यमानोदिवौकसैः ॥ ९१ ॥
त्रिमासंयोजपेन्नित्यमष्टोत्तरसहस्रकं ॥ सहस्राशरभेशस्यसारूप्यंलभतें
बिके ॥ ९२ ॥ षण्मासंयोजपेद्देविसर्वसिद्धिप्रदायकं ॥ ममलोकेतुसंपूज्यवि
ष्णुलोकेतथैवच ॥ ९३ ॥ ब्रह्मलोकेचरमतेसर्वत्रतान्निवार्यते ॥ इंद्राग्नियम

शा·क·
॥९॥

कोटीशराजलेशापर्वतैःसदाः॥९४॥आद्येशानकलक्ष्मीशैर्दिक्पालैश्चपूज्यते
॥आदित्यसोमपृथ्वीज्याबुधश्रीगुरुभार्गवैः॥९५॥पूज्यतेसग्रहैःसर्वैःशनि
राहुर्ककेतुभिः॥ऋत्वंगिरपुलस्त्यैश्चपुलहात्रिमरीचिभिः॥९६॥दक्षकश्य
पभृग्वाद्यैःयोगिभिश्चसपूज्यते॥भैरवैर्वसुभिरुद्रैरादित्यैर्वालषिल्यकैः॥९७॥
दिग्गजैश्चमहानागैर्दिव्यास्त्रैर्दिव्यवाहनैः॥माहेश्वरैर्महारत्नैःकामधेनुसु
रद्रुमैः॥९८॥सरिद्भिःसागरैःशैलैःदेवताभिस्तपोधनैः॥दानवैःराक्षसैः ॥९॥
क्रूरैःगान्धर्वैःसिद्धकिन्नरैः॥९९॥यक्षविद्याधरैर्नागैरप्सरोभिश्चपूज्यते॥